CC-0. In Public Domain. Digitization by eGangotri/Sarayu Trust
CC-0. In Public Domain. Digitization by eGangotri/Sarayu Trust Funding IKS-MoE Grant 2

ज्योतिष

नं. [illegible]

१
—
१.

Kashi Maharani Collection, Ramnagar Fort, Varanasi
Kashi Maharani Collection, Ramnagar Fort, Varanasi

Digitization by eGangotri/Sarayu Trust

१ ॐ श्रीगणेशाय नमः ॐ नमस्तुत्य महादेवं सर्वशास्त्रविशारदं भविष्यदर्थबोधाय
वक्ष्यंते पंचपक्षिणाम ॥१॥ अनेन स्वरसारेण लोके कालत्रयं प्रति फलाफलानि वक्ष्यं-
ते कार्याकार्येषु निश्चये ॥२॥ आगतं पृछकं दृष्ट्वा दैवज्ञः सावधानतः पृछकोत्थितकर्मा-
णि तत्सर्वं विचारयेत ॥३॥ आहूतानां सकलज्ञेन प्रयस्मात्क्षरतोपि च ज्ञातव्यं चेष्टया चै-
व खगानां बुद्धिमत्तमैः ॥४॥ [redacted] दुर्जनानां रक्षैः हीनं ककाराणां पक्षविन्यसेन त्रि-
भिर्भागं विजानीयात् लब्धशेषे क्रमाणि हि ॥५॥ पंचभूतेषु दस्राद्रि गैः वानि वलानि च १

Kashi Maharani Collection, Ramnagar Fort, Varanasi

CC-0. In Public Domain. Digitization by eGangotri/Sarayu Trust
CC-0. In Public Domain. Digitization by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2

कालो वर्णं बलं मैत्रं धातुर्लिंगाद्यक्रमात् ॥६॥ यस्य नामाक्षरस्यादौ स्वर्मात्रं तु उच्यते अ
कारादिस्वराणां च पंचानां च विचारतः ॥७॥ अकारः स्वेन आख्यातः इकारः पिंगलस्तथा
उकारो वायसश्चैव एकारस्ताम्रशेखरः ॥८॥ ओकारोनिलकंठश्च वर्णानां पक्षिसंज्ञकाः क्षि
तिर्भ्रगमरेज्यश्च जलं दक्षिणादिग्भृगुः ॥९॥ वह्निपश्चाद्धरासूनुः वायुर्दिक् चंद्रमस्तथा
गगने च चतुष्कोणं मध्ये सूर्यसुतः क्रमात् ॥१०॥ क्षितिर्ब्रह्मा जले विष्णुस्तथा रुद्रो हुताशने
ईश्वरः पवनो देवस्तथाकाशो महेश्वरः ॥११॥ अंअःश्च स्वर्निपूर्वैस्स नक्षत्रमुच्यते

Kashi Maharaj Collection, Ramnagar Fort, Varanasi
Kashi Maharani Collection, Ramnagar Fort, Varanasi

CC-0. In Public Domain. Digitization by eGangotri/Sarayu Trust
CC-0. In Public Domain. Digitization by eGangotri/Sarayu Trust Funding IKS-MoE-Grant-2

तक्रमाहिषदुग्धश्च पंचपंचननतःपरं १२ प्राक्तेन पिंगलोपाश्च पश्चिमे काक उच्यते
उत्तरे नामचूडश्च मयूरो मध्यमे तथा १३ श्येनो मीनौ तथैवं प्राग्वै पिंगलो याम्यनैरृतोः वाय
स्यः पश्चिमे वापु द्दृशो टीचीचकुक्कुटः मध्ये मेनीलकंठस्यादिग्दृव्यास्थितनिश्चयः १४
मकाद्द्मे मठसिंहालिकन्यायुग्मकर्कटे उकारे धनमीनौ च एकारस्तुतुलावृषौ १५
ओकारो मृगकुंभौ च इत्येतद्राशिपश्चिकः मेहूः श्च धनुमीनौ पिंगलस्तुतुलावृषौ १६
काकोवृश्चिको मेषः कुक्कुटो युग्मकुंभकौ मयूरस्य घटोनक्रःकुलैवे पक्षिसंश्रयः १७

Kashi Maharani Collection, Ramnagar Fort, Varanasi
Kashi Maharani Collection, Ramnagar Fort, Varanasi

CC-0. In Public Domain. Digitization by eGangotri/Sarayu Trust
CC-0. In Public Domain. Digitization by eGangotri/Sarayu Trust Funding IKS-MoE Grant 2

प्रथमो रविर्क्रौंचो द्वितीयाचंद्रचंद्रभौमेनतायागुरुवारश्चचतुर्थीभृगुवासरःपंचमीरविसुतश्च
पक्षिणांक्रमलोदिनंश्येनोर्कभूमेरविजेनुकाकोशिखीभृगुकुकुठकोतसोमे वाचस्पतिःपिंग
लेकृत्स्नपक्षेसूर्यो स्यातखद्युटिकाप्रमाणं भूतेमयूरकुर्म्वौचकुकुटोवर्तमानकः वायसःश्ये
नरारस्यातौवर्तमानभविष्यतौ १८ श्येनोहिरण्यवर्णश्चपिंगलोशुक्लवर्णकःकाकोर
कोपाचित्रश्चकुकुटःश्याममयुरःशिखी १९ ऊर्द्ध्वदृष्टिश्चजीवश्चअधोदृष्टिश्चमूलकं ।
समदृष्टिभवेद्धातुद्रूतेचेष्टस्यलक्षणं २० काकोवलीतुसर्वेभ्योतस्मात्श्येनोहिदुर्बलः ।।

Kashi Maharani Collection, Ramnagar Fort, Varanasi
Kashi Maharani Collection, Ramnagar Fort, Varanasi

CC-0. In Public Domain. Digitization by eGangotri/Sarayu Trust
CC-0. In Public Domain. Digitization by eGangotri/Sarayu Trust Funding IKS-MoE Grant-2

कुकुरो हु वै लो[illegible] स्म[illegible]त्तन्म्यई रितः २१ नील कंठ श्वस वैर्भ्यो दुर्वलो भवति ध्रुवं मित्रं मयू
र स्येन स्य शत्रु कुकुटवायसौ सुहृदौ पिंगल स्येनौ मध्यम[illegible] श्रेष्ठौ काकः स्यरात्रवो नि
त्यं पिंगलः स्येन कुकुराः कुकुरस्य रिपुर्नित्यं मयूरस्य च पिंगलः कुकुरस्य रिपुस्यात्सदा
स्येन वायसौ नीलकंठस्य सुहृदौ सदा कुकुट पिंगलौ २४ स्येनो मूलं भवे कुर्ज्वो जीव धातु सु
वायसः कुकुरो मूलजीवौ तु वधातु शि खंडिधा क २५ स्येनो नरो व धा कुर्ज पुरुषो वायसो तथा
कुकुरो स्त्री पुमा सौ तु शिखिंडी कवलेक्षणः २६ चष्पाद पिंगलो ज्ञेयो द्विपदो स्येन वायसौ ना[illegible]

Kashi Maharani Collection, Ramnagar Fort, Varanasi
Kashi Maharani Collection, Ramnagar Fort, Varanasi